ममयपदः॥ दीपं गृहाण मे दत्तं कल्याणं कुरु सर्वदा॥ अनेन दीप
दानेन। श्री कार्त्तवीर्यार्जुन। कवच मंत्रस्य भगवान् दत्तात्रेय ऋषिर
नुष्टुप्छन्दः श्री कार्त्तवीर्यार्जुनो विष्णुश्चक्रवर्त्ती देवता॥ फ्रों बी
जं॥ क्लीं कीलकं॥ ह्रौं वेधकं॥ स्वाहा शक्तिः ममाभीष्टसिध्यर्थे जपे
विनियोगः॥ ॥ अथ न्यासः॥ ॐ दत्तात्रेयप्रियतमाय अंगुष्ठाभ्यां
नमः॥ ॐ माहिष्मतीनाथाय तर्जनीभ्यां नमः॥ ॐ रेवाजलक्रीडा
नन्दाय मध्यमाभ्यां नमः॥ ॐ हैहयाधिपतये अनामिकाभ्यां नमः

NEPAL ARCHIVES 1.077

ॐ वीं ह्रराय कनिष्ठाभ्यां नमः॥ ॐ सहस्रबाहवे करतलकरपृष्ठाभ्यां
नमः॥ एवं हृदयादि॥ ॐ दत्तात्रेयप्रियतमाय हृदयाय नमः॥ ॐ माहिष्म
तीनाथाय सिरसे स्वाहा॥ ॐ रेवाजलक्रीडानन्दाय शिखायै वौषट्॥ ॐ
सहस्रबाहवे अस्त्राय फट्॥ ॐ श्रीं ॐ क्रौं श्रौं गुष्ठाभ्यां नमः॥ ॐ ऐं ह्रीं क्लीं
तर्जनीभ्यां नमः॥ ॐ ह्रूं भ्रूं श्रौं मध्यमाभ्यां नमः॥ ॐ ऐं ह्रीं क्लो अनामिकाभ्यां
नमः॥ ॐ श्रौं श्रीं ह्रूं कनिष्ठकाभ्यां नमः॥ ॐ अस्त्राय फट् कार्त्तवीर्जार्जुन
यनम करतलकरपृष्ठाभ्यां नमः॥ ॐ श्रीं श्रौं क्रौं हृदयाय नमः॥ ॐ ऐं ह्रीं

क्लीं सिरसो स्वाहा॥ ॐ ह्रूं भ्रूं श्रौं सिखायै वौषट्॥ ॐ ऐं ह्रीं क्लौं कवचाय हूं
॥ ॐ श्रौं श्रीं ह्रूं नेत्रत्रयाय वौषट्॥ ॐ अस्त्राय फट् कार्त्तवीर्यार्जुनाय न
मः अस्त्राय फट्॥ इति द्विन्यसन॥ ॥अथाक्षरन्यासः॥ ॐ श्रौं हृदय
ॐ क्लौं उदरे॥ ॐ व्रीं नाभौ॥ ॐ क्लीं जठरे॥ ॐ भ्रूं गुह्ये॥ ॐ ब्लीं द्रुवौ॥ ॐ ह्रीं जा
न्वौ॥ ॐ क्रौं पादयोः॥ ॐ श्रौं मूर्द्धि॥ ॐ ह्रूं भ्रूवौ॥ ॐ फट् हृदये॥ ॐ कों दक्षि
णकर्णे॥ ॐ नं वामकर्णे॥ ॐ वीं दक्षिणनेत्रे॥ ॐ र्यां वामनेत्रे॥ ॐ र्जुं नासिका
यां॥ ॐ नां वक्त्रे॥ ॐ यं कण्ठे॥ ॐ नं दक्षिणबाहौ॥ ॐ मं वामबाहौ॥ ईत्यक्ष

रन्यासः ॥ ॥ अथ ध्यानं ॥ अव्यात्सर्वभयात्प्रभाकरनिभः प्रद्योतनो द्योत
नः स्वर्णोत्सृक्परिवीतकंधरधरो रक्तांशुको भीखवान् नानाकल्पवि
भूषितः करसहस्राढ्यो बाणासनो वा नानाढ्यसहस्रबाहुरनिशं भूवल्ल
भो नः प्रभुः ॥ सप्तद्वीपैकनाथः सवितृसमरुचिः सर्वदुष्टांतकोनः पाया
दुज्ज्वलाक्षैः रथवरनिलयस्थूलकायोतिभीमं ॥ वायांतेभ्रिलोकीकरव
नधनुषोनिः सोनैश्च समानः सश्रीमान्कार्त्तवीर्योनिखिलजनपनताघ्रिंपु
जः क्षिप्रकारी ॥ सहस्रबाहुं सशरं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलं ॥ चौ

राद्दिदुष्टभयनाशनमीष्टदं तं देवं महामत्यविजृंभनकार्त्तवीर्यं ॥ इतिध्या
त्वा मंत्रं पठेत् ॥ ॐ श्रौं वीं फ्रों क्लीं भ्रूं आं क्रों श्रीं हुं फट् कार्त्तवीर्यार्जुनाय
नमः ॥ ततो साधारणध्यानं ॥ ॥ दक्षेपंचशतं वाणाँ वामेपंचशतं धनु
: ॥ यो बिभर्त्ति स पात्वस्मान् विघ्नव्यालशताकुलान् ॥ ॥ ॐ नमो भग
वते कार्त्तवीर्यार्जुनाय सहस्रबाहवे अमित्रविक्रमाय सर्वदुष्टचौरद
मनाय चतुर्वाद्धनागमान् चौरसमूहान् आकर्षयाकर्षय घातय घा
तय मारय मारय मोहय मोहय उच्चाटय उच्चाटय मम सर्वजनवशी

कुरु कुरु मम अमुक स्वामिने वशी कुरु कुरु मम अमुक शत्रुं वशी कुरु कु
रु ॐ ह्रां ह्रीं ह्रूं कार्त्तवीर्य्यार्ज्जुनाय हूं फट् स्वाहा ॥ ततो गायत्रीं जपेत् ॥ ।
ॐ कार्त्तवीर्य्यार्ज्जुनाय विद्महे सहस्रकराय धीमहि तन्नोर्ज्जुनः प्रचोदया
त् ॥ ॥ सर्व्वमन्त्रप्रयोगेषु जपव्येस्माहितार्थिभिः ॥ गायत्रीजपमात्रेण
मन्त्रवीर्य्यप्रवर्द्धते ॥ ततः अस्त्रोपसंहरणं जपेत् ॥ ॥ ॐ अस्त्रोपसंहर
णमन्त्रस्य भार्गवऋषि सविता देवता गायत्री छन्दः आत्मन अस्त्रोपसंहर
णमन्त्र जपे विनियोगः ॥ ॥ ॐ सोहमर्कपरंज्योतिर्हरं शिवः ॥ आत्मज्योः

तिरहं शुक्रः ज्योतिरसोहमो ॥ इति गायत्री अस्त्रोपसंहरणं च यथाशक्ति ज
पित्वा कवचं पठेत् ॥ ॥ श्रीदेव्युवाच देवादिदेव सर्वज्ञ सर्वभूतहिते र
त ॥ केन रक्षा भवेन्नृनां भीतानां विविधापदि ॥ १ ॥ राजचौराग्निपीडासुः श
स्त्राग्निविषपातनेः ॥ मारीदुःखप्रपीडासु ग्रहरोगभयेषु च ॥ २ ॥ ज्वरापस्मा
रपीडासु सिंहव्याघ्रनिपातने ॥ राक्षसासुरवेताल पिशाचप्रेतपातने ॥ ३
महाभय महानाशे महाबाते महार्णवे ॥ महामृत्युर्भये घोरे महाकलहपा
तने ॥ ४ ॥ केनापायेन शान्तिः स्यात् साधकानां महेश्वर ॥ अनष्टव्याख्यावन

रूप्यशुननागमः ॥ सर्व्वोकर्षणसंक्षोभः सर्व्वसंहननं तथा ॥ भवत्यभीष्टं ज
पणां केन तद्वद मे शिव ॥ ६ ॥ ईश्वर उवाच ॥ शृणु गुह्यतमं दे
वि गोपनीयं प्रयत्नतः ॥ अवाचेमपि वक्ष्यामि तव लोकहिताय वै
॥ ७ ॥ कवचं कान्तिवीर्यस्य सांगावरणकं क्रमात् ॥ स्वमूर्त्तिश्च समं
वै घेसजयध्यानपूर्व्वकं ॥ ८ ॥ सहस्रादित्यसंकाशे नानारत्नसमु
ज्ज्वले ॥ माल्यध्वजपताकाढ्ये तुरंगायुतभूषिते ॥ ९ ॥ महासंवर्त्तकाग्नि
घि भीमरावविराविणि ॥ समुद्भूतमहाट्टहास वितानित वियत्यठे ॥

१० ॥ कणत्किंकिणिकाजाले चलच्चामर[illegible]मण्डिते ॥ महारथवरो
दीप्ते नानायुधविराजिते ॥ ११ ॥ सुस्थितं विपुलोदारं सहस्रभुज
मण्डितम् ॥ वामे रुद्रं दण्डकोदण्डध्यानमपरिश्रान्तम् ॥ १२ ॥ किरी
टहारमुकुटकेयूरवलयांगदैः ॥ हुडिकोदरवं[illegible]मौञ्जीनूपुरका
ङ्चिभिः ॥ १३ ॥ भूषितं विविधाकल्पैः भास्वैः सुमसौरभैः ॥ विद्युद्वह्नि
त्यसंकाशं कुण्डलद्वयसोभितं ॥ १४ ॥ आवधकवचंवीरं सुप्रसन्न
मुखाननं ॥ धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयं ॥ १५ ॥ सर्व्वेस्त्र

क्षयकरं दुष्टव्याधिविनाशनम् ॥ सर्वसंपत्प्रदातारं विजयश्रीनि
षेवितं ॥१६॥ सर्वसौभाग्यदं भद्रं शत्रूणां भयनाशनं ॥ दिव्यमार्त
ण्डलेपाढ्यं सर्वलक्षणसंयुतं ॥१७॥ एवनागाश्वपादातं वेदमध्य
गमीश्वरं ॥ वन्दे चक्रवर्त्तिनां माद्यं लोकैकपालकं ॥१८॥ सामान्तो
दितसाहस्र दिवाकरसमद्युतिम् ॥ महायोगबलैश्वर्यं कार्त्यवी
तजगत्त्रयं ॥१९॥ श्रीमच्चक्रहरे साक्षात् दत्तात्रेयमहावली ॥ सम्यग
माविभेदेन ध्यात्वा रक्षानुदारयेत ॥२०॥ दत्तात्रेय ऋषिः श्लोकोनु

ष्टुप्छन्दः प्रकीर्त्तितं ॥ कार्त्तवीर्यार्जुनो विष्णुचक्रवर्त्ती च देवता
॥२१॥ विनियोगो स्य रक्षायै सर्वतः परिकीर्त्तितः ॥ सर्वदुष्टविनाश
य सर्वार्थस्य च सिद्धये ॥२२॥ अथ दिग्बन्धनी ॥ ॥ ॐ अग्रयां गन्ध
र्वयः पंचयातुमांसस्फटिकोज्वलाः ॥ आग्नेशासुरवायव्या कोणेषु हय
यादिकाः ॥ सर्वतस्तु ज्वलद्रूपा वरचर्मासियाणयः ॥ अव्याहतबले
श्वर्य शक्तिसामर्थ्यविग्रहाः ॥२३॥ क्षेमंकरी शक्तिचक्रे वीराणां मद
नेजनः ॥ प्राचीं दिशं रक्षतु मे बाणो बाणासनायुधः ॥२४॥ श्रीकरी

शक्तिम हितो. मारिमद विभंजनः ॥ शरचापधरः श्रीमान् रक्षा भवतु
मे दिशि ॥ २६ ॥ महावज्रांकुशीयुक्तः शत्रूणां मदभंजनः ॥ मादेहु वा
यव्यां पातु मम भावदसी दिशि ॥ २७ ॥ यशस्विन्या समायुक्तो दैत्या
नो मदभंजनः ॥ कोदंडेषुधरः सौम्यां दिशं मे परिरक्षतु ॥ २८ ॥ आ
शुः कीपुतश्चापः वाणवान् दुष्टनाशनः ॥ प्रज्ञाकरी शक्तियुक्तो वा
णवान् दुष्टनाशनः ॥ २९ ॥ परिरक्षतु मे सम्यक् विदिशं चैत्रमानविं ॥
विद्याकरी समायुक्तः सुमहान् दुःखनाशनः ॥ पातु मे नैऋतीं वापवा

योर्विदिशमीश्वरः ॥ ३० ॥ धनकरी समायुक्तो महादुःखितनाशनः ॥
दुष्टासने षधकायातु विदिशो मम वायवि ॥ ३१ ॥ आयुकार्यायुतः श्रीमान्
महाभयविनाशनः ॥ गोषेकुधारी शैवी मे विदिशं परिरक्षतु ॥ ३२ ॥ विज
यः श्रीयुतः साक्षात् सहस्रारधरो विभुः ॥ दिशाश्च सर्द्धावतु मे महाभयवि
नाशन ॥ ३३ ॥ शंखमलुमहाशक्ति संयुतो ह्यधरां दिशं ॥ परिरक्षतु मे दुःख
ध्वान्तसमेद्ध भास्करः ॥ ३४ ॥ महायोगाग्नियायुक्तः सर्वदिक्वज्रमंडलम्
महायोगेश्वरः पातु सर्वतो मम पद्मयुक् ॥ ३५ ॥ एतानि दिग्मूतयो दिव्या

कवु

रक्तमाल्यानुकारेताः ॥ प्रधानदेवरूपाः पृथक्कायवो स्थिता ॥ ३६ ॥ शङ्ख
यः पद्महस्ताश्च नीलेन्दीवरसन्निभाः ॥ शुक्लमाल्यानुलेपनाः सुसितिप्रति
लोकोज्वला ॥ ३७ ॥ तत्पार्श्वे ईश्वराः श्वश्व वाहनाश्च धनुर्धराः ॥ स्वस्वदि
क्षु स्थिता पातु मा निद्रा क्षुधा महाबला ॥ ३८ ॥ एता लक्ष्यस मारव्याताः स
र्वावरणदेवता ॥ सर्व्वतो मां सदा पातु सर्वशक्तिसमन्विताः ॥ ३९ ॥ हृद
येवोदरे नाभौ जठरे गुह्यमण्डले ॥ ऊरुयुग्मानुयादेषु मूर्द्धि मस्तगलेषु
नः ॥ ४० ॥ कर्णाक्षिनासिकावक्त्र कण्ठवाकहृदयेषु च ॥ दशवीजात्मकाः

मंत्रास्यशः संवृद्धिकारकाः ॥ ४१ ॥ तेजोरूपाः स्थिताः पातु वोढ्वा सुरवरडुमा
ः ॥ दशवान्ये महावर्णा मंत्ररूपा महोज्वलाः ॥ ४२ ॥ व्यापकत्वेन यां त्वस्माना
पादतलमस्तकं ॥ कवचं ॥ ह्रें कार्त्तवीर्य्यार्जुनमाहि· शान्तीनाथसहश्रारेष्ट
फट् ॥ ॥ कार्त्तवीर्य्यः शिरः पातु ललाटे हैहयेश्वरः ॥ ४३ ॥ सुमुखो मे मुखं पा
तु कर्णौ व्याप्तजगत्त्रयः ॥ सुकुमारो हनू पातु ग्रीवायां मे धनुर्द्धरः ॥ ४४ ॥ न
यने पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥ अंधरोष्ठौ सदा पातु ब्रह्मज्ञे
यो द्विजाकृति ॥ ४५ ॥ पातान्तर ॥ ओं श्रोष्ठयुग्मं सदा पातु ब्रह्मज्ञेयो द्विजो

कवि ॥ सर्व्वशास्त्रकलाधारो जिह्वां चिबुकमव्ययः ॥ दत्तात्रेयप्रियः कंठ
स्कंधौ राजकुलेश्वरः ॥४६॥ भुजौ दशास्यदर्प्पघ्नो हृदयं मे महाबलः ॥ कु
क्षिं देशं तु मे विद्यावक्षः पातुं जय ॥४७॥ कौ सर्व्वार्थदः पातु कराग्राणि
जगत्प्रियः ॥ रेखां तु लीलासः नृत्तो जठरे मे मिरक्षतु ॥४८॥ वीरश्रूरस्तु मेनं
भिः पार्श्वं मे सर्व्वदुःखहा ॥ सहस्रभुजभृत्पृष्ठं सप्तद्वीपाधिपः कटिं ॥४९
गुह्यं जितेन्द्रियः पातु सक्थिनी योगिवल्लभः ॥ ऊरू मोक्षपतीनाथो जानु
नी वल्लभोत्तुवः ॥५०॥ जंघे वीरप्रियाः पातु गुल्फौ पातु मनोजवः ॥

पातु सर्व्वायुधधरः सर्व्वांगं सर्व्वसन्धिषु ॥५१॥ सर्व्वदुःखान्नवाः पातु बाल्व
ष्ठककलेवरं ॥ रोमकूपाणि सर्व्वाणि पातु मे साध्यविग्रहः ॥५२॥ प्राणा
दिदशजीवेमा सर्व्वशिष्टेष्टदोवतु ॥ वशीकृतेन्द्रीयःग्रामः पातु सर्व्वेन्द्रि
याणि मे ॥५३॥ अनुक्तमपि यत्स्थानं शरीरान्तर्वहिश्च यत् ॥ तत्सर्व्वं पातु
मे सर्व्वं लोकनाथेश्वरेश्वरः ॥५४॥ वज्रोल्लासितं वेदं शरीरं कवचावृ
तं ॥ बाधाशतविनिर्म्मुक्तं मस्तकेभयवर्जितं ॥५५॥ वध्वेदं कवचं दिव्य
मभेद्यं देहयस्यतुः ॥ विचरामि दिवारात्रौ निर्भयेनान्तरात्मना ॥५६॥ क

वच॥ ॥राजद्वारे महादुर्गे मार्ज्जरादिशंकुले॥ विषमे विपिने घोरे सिं-
हव्याघ्रनिपातिते॥ ५७॥ संग्रामे शस्त्रसंपाते दावाग्निगिरिकंदरे॥ गह्व-
रे सर्प्पसंकीर्णे सध्याकालेन्द्रपातये॥ ५८॥ विवादे विपुलावर्त्ते समुद्रेच
नदीतटे॥ परियेधि शातकीर्णे दैत्यदस्युगणावृते॥ ५९॥ सर्व्वस्वहरणे
चैव प्राणप्राणत्ययसंकटे॥ नानारोगज्वरावेशे पिशाचप्रेतपातने॥ ६०॥
मारिदुःस्वप्नपीडासु क्रूरे विश्वासघातके॥ सरीरेच महादुःखे मानसेच
महाज्वरे॥ ६१॥ आधिव्याधिभयघोरे ज्वरोपद्रवकेऽपच॥ नमस्येतु इयं वि-

श्विके वचेनावृतस्य मे॥ ६२॥ आगन्तुकामन रवितानस्मरेत्वा विलुंपके-
न॥ निवारयतु देहे ऊरु सहस्रेणामाहारथ॥ ६३॥ स्वकरोद्धृतसाहस्रप-
शावद्धान्सुदुर्ज्जयान्॥ संरुद्धगतिसामर्थ्यात्करोतु कृतवीर्य्यजः॥ ६४॥
सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान्॥ राजसूयमणिः क्षिप्रं
करोत्वसिविरोधकान्॥ ६५॥ खड्गसाहस्रदलितान्सहस्रमुद्गरार्द्दि-
तान्॥ वैरादिदुष्टसंघातान्करोतु कमलेक्षणः॥ ६६॥ स्वशंखनादसं-
त्रस्तान्सहस्रारविदारितान्॥ करोतु सर्व्वदुष्टौघान्सहस्रारसहस्रभृ

रस॥१

म॥६७॥ कृतवीर्य्यसुतो राजा सहस्रभुजमण्डितः॥ अवतारो हरेः साक्षा
त्पालयेत्सकलं मम॥६८॥ कार्त्तवीर्य्यार्ज्जुनो नाम राजा बाहुसहस्रवान्
॥ तस्य स्मरणमात्रेण लोको भवति निर्भ्भय॥६९॥ सोकभवन्नो करक्षार्थ
मंशाच्चक्रे हरेर्भुवि॥ नत्वमामि महावीर्य्यमर्ज्जुनं कृतवीर्य्यजं॥७०॥ सह
स्रबाहुं सशरं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम्॥ चौरादिदुष्टभयना
शनमिष्टदं तं ध्यायन्महाबलविजृम्भितकार्त्तवीर्य्यं॥७१॥ सव्ये पंचशतैः
बाणान् वामे पंचशतं धनुः॥ त्वामेव शरणं प्राप्तं सर्व्वतो मम रक्ष मां॥७२॥

कार्त्तवीर्य्य महावीर्य्य सर्व्वदुष्टविनाशन॥ सर्व्वत्र सर्व्वदा तिष्ठ दुष्टाच्च
त्रायया हि मां॥७३॥ उत्तिष्ठ दुष्टदमन सप्तद्वीपैकपालक॥ त्वामेव श
रणं प्राप्तं सर्व्वतो मम रक्ष मां॥७४॥ दुष्टघ्न किं त्वं स्वपिषि किं तिष्ठसि वि
रयोसि॥ पाहि नः सर्व्वदा सर्व्वे भयभ्यः स्वसुतानिव॥७५॥ ये चौरा वसुह
र्त्तारो विद्वेषो ये च हिंसकाः॥ अन्यायकरणो रक्ष भकायदुराशया
॥७६॥ दुर्द्दैवदुष्टभूपालाः दुष्टामात्याश्च पापकाः॥ येच कार्य्यविलोधि
नश्च लाः परिपन्थिनः॥७७॥ सर्व्वस्वहारिणो येच शैन्यमायाविनोधरे

॥ महाक्लेशकराश्चैव दुष्टवैरिगणाश्च ये ॥ ७८ ॥ अग्निदा गरदा चौरा
वञ्चका शस्त्रपाणयः ॥ ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः ॥ ७९
॥ व्याधकाः कुपथासक्ताः ये च नानाभयप्रदाः ॥ छिद्रान्वेषरता नित्यं
यस्मान्व्याधितुमुद्यताः ॥ ८० ॥ सत्वविघ्नापहरणो बंधनादिभयप्रदाः
दुष्टाश्च विविधाकारा ये चान्ये दुष्टजातयः ॥ ८१ ॥ पिडाकरापन्नातत्तंच्छि
द्रमीहन्ति बाधितुं ॥ ते सर्वे कात्स्न्ये वीर्यस्य महाशंखप्रवाहताः ॥ ८२ ॥ स
हस्राविलयं यान्तु दुष्टदेवविमोहिताः ॥ ये दानवा महादैत्या ये यक्षा

यक्षराक्षसाः ॥ ८३ ॥ पिशाचा ये महासत्वा ये भूता ब्रह्मराक्षसाः ॥ अप
स्मारा महाये च ये महाधिष्ठितामनाः ॥ ८४ ॥ महालोहितभोक्तारो वे
तालाश्च गुह्यकाः ॥ गन्धर्वाप्सरसः सिद्धाः ये च देवादियोनयः ॥ ८५
डाकिन्यो गुह्यकाः प्रेताः क्षेत्रपाला विनायकाः ॥ महाव्याघ्र महामे
घ महातुरंगरूपकाः ॥ ८६ ॥ महागजमहासिंह महामहिषसन्निभाः ॥
ऋक्षवाराहश्वानकवानरोलूककूर्मयः ॥ ८७ ॥ महाघुरखपार्जारस
र्पगोवृषमस्तकाः ॥ नानारूपा महासत्वा नानाक्रोशसहस्रदा ॥ ८८

नानारोगकराः क्षुद्रा महावीर्या महाबलाः ॥ वातिकाः पैतिका घोराः
श्लेष्मिकाः सन्निपातिकाः ॥ १८ ॥ महेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महा
ग्रहाः ॥ स्कान्दा वैनायकाः क्रूरा एव च प्रथमसम्भवाः ॥ २० ॥ महामातृगणा
रौद्रा महामारिमसूरिकाः ॥ एकाहिका द्व्याहिकाश्च त्र्याहिकाश्च म
हाज्वराः ॥ २१ ॥ चातुर्थिकाः पाक्षिकास्तु मासा षण्मासिकाश्च ये ॥ सा
म्वत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ २२ ॥ श्वासिकाश्च महोत्पा
ता एव चैव स्वासिकाग्रहाः ॥ कुष्माण्डा जम्भका भीमा घोरा सान्निधिः

वं च काः ॥ २३ ॥ ग्रामका ग्राणाहर्त्तारा एव च बालग्रहादयः ॥ मनोबुद्धीन्द्रि
यहराः स्फोटकाश्च महाग्रहा ॥ २४ ॥ महाशनी वह्निभुजो महाकुणपभो
जनाः ॥ दिवाचरा रात्रिचरा एव च संध्या सुदारुणाः ॥ २५ ॥ प्रमत्ता मत्ता मत्त
न्वा ये मान्वाधिभुञ्जनाः ॥ ते सर्वे हैहयेन्द्रस्य धनुर्मुक्तशराधिताः ॥ २६
॥ सहस्रधाग्रणीर्यान्तु भवन्तमत्ववेलोयमाः ॥ ये सर्पा ये महानागा महा
गिरिविलेशयाः ॥ २७ ॥ कालसर्पा महादंष्ट्रा महाजगरसंज्ञकाः ॥
अनन्तकुलिकाद्याश्च दृष्टिविषमहाभयाः ॥ २८ ॥ अनेकशतशीर्षा

च॰ खेचराः पुच्छाश्च दारुणाः ॥ महाविषजलूकाश्च॰ वृश्चिकाः कर्कुटकाः
॥ ९९ ॥ आशीविषाः कालकूट॰ महाहालाहलादयः ॥ जलसर्पा जलः
व्याला॰ जलग्राहाश्च कच्छपाः ॥ १०० ॥ विषपुच्छा मत्स्यकाश्च॰ ये चान्ये जल
वासिनः ॥ स्थलजा जलजाश्चैव॰ नानाभेदशतोद्भवाः ॥ १०१ ॥ ये च षड्बिन्द
वो लूता॰ भ्रमराः शूकपुच्छकाः ॥ स्थावरा जंगमाश्चैव॰ कृत्रिमाश्च महा
विषाः ॥ १०२ ॥ गुप्तविषा गुप्तरूपा॰ मूषिका गृहगोधिकाः ॥ अपस्मारवि
षा घोरा॰ महोपविषसंज्ञकाः ॥ १०३ ॥ ये स्मान्बाधितुमिच्छन्ति॰ शरीरप्राण

नाशकाः ॥ ते सर्वे कीर्त्तिवीर्यस्य॰ खड्गसाहस्रदारिताः ॥ १०४ ॥ दूरादेव
विनश्यन्तु॰ प्रनष्टगतिसाहसाः ॥ मनुष्याः पशवो रुद्रा॰ वानरा वनगोच
राः ॥ १०५ ॥ सिंहव्याघ्रवराहश्च॰ महिषाश्च महामृगाः ॥ गजालुंगा गवय
रा॰ सभाशरभाह्वकाः ॥ १०६ ॥ शुनकाद्वीपिनः शुभ्राः॰ मार्जारा वृषलोमशाः
॥ शृगालाः श्वमाः श्येनाः गरुत्मन्तो विहंगमाः ॥ १०७ ॥ भैरुण्डा वायसा गृ
ध्राः हंसाद्याः पक्षिजातयः ॥ उद्भिजाश्चाण्डजाश्चैव॰ स्वेदजाश्च जरायुज
॥ १०८ ॥ नानाभेदकुलेजाता॰ नानाभेदस्वपविधाः ॥ ये स्मान्बाधितुमिच्छ

त्रिसंध्यास्तु दिवा निसि॥१०९॥ते क्षिप्रं कार्त्तवीर्यस्य गदासाहस्रदा-
रिताः॥ दूराद्देव विनस्यंतु विनष्टगतियो हषाः॥११०॥ ये चान्ये मम दानारे
द्विष्टा ये विद्वेषकाः॥ कृत्वा यंत्रं संकर्त्तारः कूटमाया विनश्यये॥१११॥
मारणोच्चाटनोन्माद द्वेषमोहनकारकाः॥ विश्वासघातको दुष्टा ये चर्त्वं
मिद्रुहो नराः॥११२॥ ये चाततायिनो दुष्टा ये पापा गोब्रह्मारिणः॥ दाहोप
घातगरल शस्त्रपातादिदुःखदाः॥११३॥ ध्वांक्ष वित्तप्रहरण वंधनादिभ
यप्रदाः॥ दुर्नयो विविधाकारा ये वान्ये दुष्टजातयः॥११४॥ पीडाकरा ये स

नतं क्षिप्रमीहन्निवाधितुं॥ ते सर्वे कार्त्तवीर्यस्य चक्रसाहस्रदारिता॥११
५॥ दूराद्देव विनश्यन्तु स्वयं यान्तु सहस्रधा॥ ये मेघा ये महावर्षा ये चा
न्याश्च विद्युताः॥११६॥ ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः॥ उ
ल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः॥११७॥ सूर्येन्दुकुजसौम्याश्च
गुरुकाव्यशनैश्चराः॥ राहुश्च केतवो घोरा नक्षत्राणि ग्रहास्तथा॥११८
तिथयः संक्रमा मासा हायना युगनायकाः॥ मन्वन्तराधिपाः सिद्धाः
ऋषयो योगसिद्धयः॥११९॥ निधयोऽमग्यसुसामाः पर्व्वणाद्याश्च यं द्रु

यः ॥ अनन्तो लोकपालाश्च पितरो देवसंहतिः ॥ १२० ॥ विद्याश्चैव वसुः षड्
मेदोन्याभुवनत्रये ॥ एते ते कीर्त्तिताः सर्व्वे ये चान्ये नानुकीर्त्तिताः ॥ १२१
॥ ते संतु नः सदा सौम्याः सर्व्वकाले सुखावहाः ॥ आज्ञयो कार्त्तवीर्यस्य यो
गीन्द्रस्यामितद्युतेः ॥ १२२ ॥ कार्त्तवीर्यार्ज्जुनो धन्वी राजेन्द्रो हैहयेश्वरः
॥ दत्तात्रेयप्रियश्चैव नमः सहस्रभुजमण्डितः ॥ १२३ ॥ वापिस्वक्षीरथीवाः
णी तुणी वर्मी महाबलः ॥ सुभगः सुमुखः शान्तश्चक्रवर्त्ती गुणाकरः
॥ १२४ ॥ दशास्यदर्पहारी वा लीलातग्नः सुदुर्जयः ॥ दुःखहा णहदमनो

राजराजेश्वरः प्रभुः ॥ १२५ ॥ सर्व्वज्ञः सर्व्वदः श्रीमान्सर्व्वशिष्टेष्टदुः कृती ॥
राजहंसमणियोगी सम्रद्धीपाविनायकः ॥ १२६ ॥ विजयी विश्वतोवा
ग्मी महागतिरलोलुपः ॥ रज्ञोविप्रप्रियो विद्वान्ब्रह्मगेयः सनातनः
१२७ ॥ माहिष्मतीपतिर्योद्धा महाकीर्त्तिर्महाभुजः ॥ सुकुमारो महावी
रो मारिघ्नो मदिरेक्षणः ॥ १२८ ॥ शत्रुघ्नः शाश्वतः शूरः शंखभृद्योगिव
ल्लभः ॥ महाभागवतो धीमान्महाभयविनाशनः ॥ १२९ ॥ असाध्यविग्र
हे दिव्यमायो व्याघ्रजगत्रयः ॥ सर्व्वशास्त्रकरीधारी विजोलोकवन्दितः

१३० ॥ पालिताखिलविंध्यर्थी । महाबलपराक्रमः ॥ विजयश्रीमयो मान्यो
जितारिर्मन्त्रनायकः ॥१३१॥ खड्गमुद्गरकामदः कान्तः कालघ्नः कमलेक्षण
ः ॥ भद्रवारप्रियो वेशो । विबुधो वरदो वशी ॥१३२॥ जितेन्द्रियो जितप्राणि
ः स्वच्छन्दोनन्तविक्रमः ॥ वक्रमूर्त्तिर्वक्रघ्नः संग्रामविधिपूजितः ॥१३
३ ॥ महाधनो निधिपतिः । महावेगगुरुप्रियः ॥ योगाध्यः सर्व्वरोगघ्नो रोगजि
ताखिलभूतलः ॥१३४॥ दिव्यास्त्रविद्भेयात्मा । सर्व्वगो धाम दोज्वलः ॥ स
र्वायुधधरो भीरु भद्रदया रक्तजयः ॥१३५॥ योगसिद्धो महाकायो । महाव

ष्टशताधिकः ॥ सर्व्वज्ञाननिधिः सिद्धः सिद्धिस्थानः कृतोद्यमः ॥१३६॥
इत्यष्टसैननामोस्था । मूर्त्तेयो रुद्रादिकाधि ॥ समस्तकृद्रादिरो व्याप्य । प
लयं तु वमांसदा ॥१३७॥ शेषायो मूर्त्तयोस्थो व । दिकृक्रमेनैव माश्रुराः ॥
अग्निनैऋतिवायव्य । ईशानाः पातु मे सदा ॥१३८॥ स्वस्थाः सर्वेन्द्रिया
ः सन्तु । शान्तिरस्तु सदा मम ॥ मनसो स्वास्थ्यमसंबाध्ये । मारोग्यमय राजयः ॥
१३९ ॥ दुःखहानिरविघ्नश्च । प्रजावृद्धिः सुखोदयः ॥ वांछासिद्धिश्च क
ल्याणं । मवैषम्य मनोमयं ॥१४०॥ अनालस्यमभीष्टं च । मृत्युहानिर्द्धलोच

कद्राविन्यस्ता यात्रे ॥१४६॥ पठन्ति श्रावकस्थायदुःखप्रविपणश्चति

॥ लभते वाञ्छितानर्थान् पूज्यते क्षितिः श्रीरपि ॥१४७॥ श्राम्यान सागतोप

त्रैरग्रहं कल्पवृक्षं पठेन ॥ नवन्मान स्वप्नानानि दुःस्वप्नादिकृतं भयम्॥१४

८॥ श्रौरेयदाहृतं पठ्यते न पश्चादिवनमात्मनः ॥ सप्तवारं तदाजप्ता नि

शि पश्चिमदिङ्मुखः ॥१४९॥ सप्तरात्रेण लभते न हृदयं न संशयः ॥ स

प्तविंशतिधा जप्ता पानीदिग्वदनोयदा ॥१५०॥ तदा देवासुरा निमंप

श्वत्रं निवारयेत ॥ त्रिसन्ध्ये कलदेघोर पञ्चधा च पठेद्दिनं ॥१५१॥ विज

आशा सफू कुथि
ASHA ARCHIVES
1.077

यं जायते तस्य न कदाचिन्नृपाज्जयः ॥ सम्यक् द्वादशधा रात्रौ प्रजपेद्यश्चमु
क्तये ॥१५२॥ त्रिदिनान्निगडग्रस्तो मुच्यते नात्र संशयः ॥ अनेनैव विधाने
न सर्वसाधनकर्मसु ॥१५३॥ असाध्यमपि सन्नाहात् साधयेन्मंत्रवित्त
मः ॥ यात्राकाले पठेद्विद्वान् मार्गं गच्छति यः पुमान् ॥१५४॥ न दस्युचौर
व्याघ्राद्यैर्भयं स्यात्परिपंथिभिः ॥ नित्यं गृहागतो जन्तुः कल्याणैः परिपू
र्यते ॥१५५॥ न भयं जायते तस्य दुष्टसत्वादिभिः क्वचित् ॥ सर्वरोगप्रपीडि
तेसु त्रिधा वा पंचधा पठेत् ॥१५६॥ स रोगमृत्युवेताल भूतप्रेतैर्विमुच्यते

॥ जपन्नाशेव वं कुर्याज्ज्वलेनाजलितानतौ ॥१५७॥ न वासौ दृषकृत्या
दि रोगस्फोटैः प्रबाध्यते ॥ त्रिसंध्यासु पठेद्येन त्वमासं विजितेन्द्रिय
: ॥ कालमृत्युमपि प्राप्तं जित्वा नास्त्यत्र संशयः ॥ पठेतः केवलं देवं वि
घ्नानां कृमतेतनौ ॥१५८॥ न जायंते लमूकत्वं नोपसर्गभयं क्वचित् ॥
विंशत्यर्णोक्तविधिना ध्यात्वा देवं तदात्मकं ॥१६०॥ मंत्री गुरुप्रसा
दाप्तं मंत्रराजं पठेत्पुनः ॥ कवचेनावृतो भूयो मंत्रध्यानं समाचरेत्
॥१६१॥ आदौ संबोधनं कृत्वा तन्नामस्थानपूर्वकं ॥ चतुरश्च क्रमेत्र

र्णं मुद्रां द्वीजपूर्वकं ॥ ६२ ॥ शरीरेन्यासमेवं हि यः करोति समाहित
ः ॥ यथोक्तं लभते सद्यः फलं वज्रतनुर्भवेत ॥ ६३ ॥ यथा तथैदं कव
चं कस्य चित्र प्रकाशयेत ॥ गोपनीयं प्रयत्नेन शिवस्य वचनं त
था ॥ ६४ ॥ शुभक्ताय सुशिष्याय दद्यात्सर्वस्वदायिने ॥ साधकानां
हितार्थाय यदुक्तं चन्द्रमौलिना ॥ ६५ ॥ कार्त्तवीर्यस्य कवचं यदु
क्तं वै मया तव ॥ येन संरक्षितो देवि कालेनापि न जीर्यते ॥ ६६ ॥
तस्मात्सर्वप्रयत्नेन कवचं स्य साधये सुधी ॥ ६७ ॥ इत्युमामहेश्वरे तं

त्रे उमामहेश्वरसंम्वादे महेश्वरप्रोक्तं कार्त्तवीर्यस्य कवचं संपूर्णं
॥ ॥ ॐ श्रीं ह्रीं इीं क्लौं ह्रूं द्रां द्रीं क्लौं श्रौं द्रूं फट् कार्त्तवीर्यार्जुनाय
नमः ॥ ॥ ॐ नमो भगवते भो भो कार्त्तवीर्यार्जुन ॐ श्रौं मम हृदयं
दुष्टं दारय २ छिन्धि हन २ पापं मथ २ आरोग्यं कुरु २ ह्रीं ह्रां द्रूं द्रूं फट् फ
ट् हन द्विषः ॥ १ ॥ ॐ नमो भगवते भो भो कार्त्तवीर्यार्जुन ॐ ह्रीं मम ज
न्वोः दुष्टं ० ॥ २ ॥ ॐ नमो भगवते भो भो कार्त्तवीर्यार्जुन ॐ ह्रूं मम नाभौ
दुष्टं ० ॥ ४ ॥ ॐ नमो भगवते भो भो कार्त्तवीर्यार्जुन ॐ श्रौं मम गुह्यं मा

लेदुष्टं० ॥५॥ ॐ नमो भगवते॰ ॐ ह्रीं मम उरु रागोनुयादे दुष्टं० ॥६॥
ॐ नमो भगवते॰ ॐ क्रौं मूत्रद्वि दुष्टं० ॥७॥ ॐ नमो भगवते॰ ॐ श्रीं भ्रूं गुग्र
दुष्टं० ॥८॥ ॐ नमो भगवते॰ ॐ ऐं मम कर्णाक्षिनाशिकावक्त्रकण्ठ दु
ष्टं० ॥९॥ ॐ नमो भगवते॰ ॐ ह्रूं भ्रूं वौं भ्रूं मम दुष्टं० ॥१०॥ ॐ नमो भगव
ते॰ ॐ मम कुक्षौः दुष्टं० ॥११॥ ॐ नमो भगवते॰ ॐ कों मम सर्वाङ्गे दुष्टं०
॥१२॥ ॐ नमो भगवते॰ ॐ ब्लें मम सर्वाङ्गे दुष्टं० ॥१३॥ ॐ नमो भगवते॰
ॐ वीं मम सर्वाङ्गे दुष्टं ॥१४॥ ॐ नमो भगवते॰ ॐ ग्यों मम सर्वाङ्गे दुष्टं०

१५ ॐ नमो भगवते॰ ॐ ह्रीं मम वाक्

॥१५॥ ॐ नमो भगवते॰ ॐ ज्रुं मम सर्वाङ्गे दुष्टं० ॥१६॥ ॐ नमो भगवते॰
ॐ नीं मम सर्वाङ्गे दुष्टं० ॥१७॥ ॐ नमो भगवते॰ ॐ यं मम सर्वाङ्गे दुष्टं०
॥१८॥ ॐ नमो भगवते॰ ॐ नें मम सर्वाङ्गे दुष्टं० ॥१९॥ ॐ नमो भगवते मो
मो कार्त्तवीर्यार्ज्जुनाय ॐ मं मम सर्वाङ्गेषु दुष्टं दारय २ दुरितं हन २ पापं
मथ २ आरोग्यं कुरु २ ह्रां ह्रीं ह्रूं ह्रैं फट् २ फट् हन द्विषः ॥ ॐ श्रौं वीं स्त्रीं
भ्रूं श्रीं ह्रीं क्रौं भ्रूं ऐं ह्रूं फट् कार्त्तवीर्यार्ज्जुनाय नमः ॥ ॥ ॥ कार्त्तवी
र्यः खलद्वेषी कृतवीर्यसुतो वली ॥ सहस्रबाहुः शत्रुघ्नो रक्तवासा ध

धनुर्द्धरः ॥१॥ रक्तगन्धो रक्तमाल्यो॰ राजा स्मर्तुरभीष्टदः ॥ द्वादशैतानि नामानि॰ कार्त्तवीर्यस्य यः पठेत् ॥२॥ संपदस्तस्य जायन्ते॰ जनास्तस्य वशंवदाः ॥ आनयत्यातु दूरस्था॰ क्षेमं लाभसुतं प्रियं ॥३॥ कार्त्तवीर्य महाबाहो॰ सर्वशत्रुनिवर्हण ॥ सर्वत्र सर्वदा तिष्ठ दुष्टान्माभय पाहि मां ॥४॥ सहस्रबाहुं सशरं चापं॰ रक्ताम्बरं रक्तकिरीटकुण्डलम् ॥ चौरादिदुष्टभयनाशनमिष्टदन्तं ध्यायेन्महाबलविजृम्भितकार्त्तवीर्यं ॥५॥ इति श्री कार्त्तवीर्यस्य कवच पाठस्तोत्रं समाप्तः ॥ ॥ ॥

ॐ श्रीगणेशाय नमः ॥ ॥ श्रीवगलामुखीदेव्यै नमः ॥ ॥ अथ व
गलामुखीदीपदानविधिलिख्यते ॥ ॥ नैमित्य ॥ न्यास षडंगन
॥ जलशोधनं निर्घशुद्धिशोधनं स्नानादिविस्तीर्ण्यते ॥ ॥ सं
कल्पयाय ॥ ॥ अद्यश्वेतवाराहादि ॥ अद्य अमुकगोत्र अमु
कनामयस्य श्रीवगलामुखीसुप्रीत्यर्थं वादिप्रतिवादिनां वा
वैमुखं गतिमतिस्तंभनं अमुककार्यप्रसिद्ध्यर्थं दीपदा
नपूजनं अहं करिष्ये ॥ ॥ आदौ गणेशपूजा होय ॥ ॥ प

नानोसिद्धः सूर्यार्घ ॥ वाकपुर्द्धवन ॥ रुद्रदानं वेः उदमदर्शनः
॥ पुष्पै नमः ॥ गुरुन्नमस्कार ॥ न्यासार्घपात्रपूजा मपूजा ॥ मोद
निफय ॥ माहिलिनि पठे ॥ येववलि ॥ त्रिदेवादिमूलस्थानान्तं पू
जा ॥ नमो विशेषवगलामुखीया मूलन्यासः ॥ ॥ ॐ अस्य श्रीव
गलामुखीमंत्रस्य नारद ऋषये नमः ॥ शिरसे ॥ गौं यत्री छन्द
से नमः ॥ मुखे ॥ श्रीपीताम्बरा वगलामुखीदेवतायै नमः ॥ हृदि
ह्लीं बीजाय नमः ॥ गुह्ये ॥ स्वाहा शक्तये नमः ॥ पादयो ॥ मम मन्त्र

णीवार्ह्मरवंगतिमतिस्तंभनार्थेजपेविनियोग ४॥ ॥अथ
कराङ्गन्यास ४॥ ॥ऐं ह्रां अंगुष्ठाभ्यांनम ४॥ऐं ह्रीं तर्जनीभ्यां
नम ४॥ऐं ह्रूं मध्यमाभ्यांनम ४॥ऐं ह्रैं अनामिकाभ्यांनम ४॥ऐं
ह्रौं कनिष्ठाभ्यांनम ४॥ऐं ह्रः करतलपृष्ठाभ्यांनम ४॥एवं हृद
यादिन्यास ४॥ ॥ततोपीठपूजा॥ ॥ह्रीं आधारशक्तयेन
म ४॥ट॥स्वर्णसिंहासनायनम ४॥महावीरवैर्याभनायनः
म ४॥ ॥ध्यानं॥ॐ गंभीरांचमदोन्मत्तां तप्तकांचनसंनि

भां॥चतुर्भुजांत्रिनयनीं कमलासनसंस्थिता॥मुद्गरंदक्षि
णेपाशं वामेजिह्वांचवज्रकम् ध्यानपूर्वंनम ४॥ ॥आवा
हनादि प्राणप्रतिष्ठा॥ ॥आंह्रींक्रोंहंस ४ श्रीबगलामुखी
देव्याप्राणाइहप्राणस्थित ४ आंह्रींक्रोंहंस ४ श्रीबगलामुखी
देव्याजीवइहजीवस्थित ४ आंह्रींक्रोंहंस ४ सर्वेन्द्रियाणि
सात्वत्रमनोबुद्धिचित्ताहंकाराघ्राणश्रोत्रत्वक्चक्षुजिह्वा
प्राणाइहैवागत्यसुखंचिरंतिष्ठन्तु २ स्वाहा ३॥ ॥आसनं॥

पाद्यादि ४ धुप ४ दिप ४ नैवेद्य ४ फल ४ ताम्बुरादि ४ र्च्चयेन् ॥ ॥ श्री वग-
लामूख्वी देव्यै नमः ४ ॥ पुनरावमन ॥ पीताक्षतपुष्पेञ्जल्याञ्जलि ३ ह्रीं
श्री वगलामूख्वी देवीञ्ज्याञ्जलिपुष्पञ्जी पादुकां पुजयामि ३ ॥ व
लि ॥ योनिमुद्रा ॥ थन्यत्रिकोने ॥ पलिवारपुजा ॥ षट्कोणे ॥ ह्रीं सुभ
गायै नमः ४ ॥ ह्रीं भगावहायै नमः ४ ॥ ह्रीं भगसिद्धायै नमः ४ ॥ ह्रीं भग
मालिन्यै नमः ४ ॥ ह्रीं भगसपिन्यै नमः ४ ॥ ह्रीं भगरियातिन्यै नमः ४
इति षट्कोणे ॥ ॥ ततो अष्टपत्रे पूजा ॥ ह्रीं अब्रह्माण्यै नमः ४ ॥ ह्रीं

के माहेश्वरी नमः ४ ॥ ह्रीं वैकौमारी नमः ४ ॥ ह्रीं वैस्नुवी नमः ४ ॥ ह्रीं ते
वाराही नमः ४ ॥ ह्रीं यैइन्द्रायण्यै नमः ४ ॥ ह्रीं यैचामुन्डायै नमः ४ ॥ ह्रीं श्रः
महालक्ष्मी नमः ४ ॥ इति अष्टपत्रे ॥ ॥ अथषोडसपत्रे पूजा ॥ ओं मं
गलायै नमः ४ ॥ ओं स्तम्भनै नमः ४ ॥ ईं हं दन्यै नमः ४ ॥ ॐ ह्रीं मोहिन्यै न
मः ४ ॥ ॐ ऐं वस्यायै नमः ४ ॥ ॐ ऐं श्रीं यलायै नमः ४ ॥ ॐ अं वलाकायै नः
मः ४ ॥ ॐ अं भूधरायै नमः ४ ॥ ॐ कल्मषायै नमः ४ ॥ ॐ धात्रै नमः ४
॥ ॐ ऐं कमलायै नमः ४ ॥ ॐ ऐं कालकर्षिण्यै नमः ४ ॥ ॐ श्रीं भ्रामिकायै

नमः॥ॐ श्रीं महंगमनायै नमः॥ॐ श्रीं भोगमल्लायै नमः॥ॐ श्रीं माविर्क
यै नमः॥ वलि॥ ॥भूगृहे॥ॐ गीं गणायनये नमः॥ॐ वीं वटुकायै
नमः॥ॐ यीं योगिनिभ्यो नमः॥ॐ क्षीं क्षत्रपालायै नमः॥ वलि॥ ॥
नतोद्वारे पूजा॥ लीं इन्द्राय नमः॥ रीं अग्नेय नमः॥ मूं जमाय नमः॥
क्षुं नैऋत्याय नमः॥ वुं वरुणाय नमः॥ यूं वायुव्य नमः॥ सूं कुवेरा
य नमः॥ ह्रूं ईशानाय नमः॥ विष्णुवे नमः॥ ब्रह्मणे नमः॥ ॥नद्वा
रे पूजा॥ वें वक्राय नमः॥ शं शंखाय नमः॥ दं दण्डाय नमः॥ खं खड्गा

य नमः॥ पां पाशाय नमः॥ क्रौं अंकुशाय नमः॥ गं गदायै नमः॥ त्रि
त्रिशूलाय नमः॥ वं वज्राय नमः॥ पं पद्माय नमः॥ ॥वतुद्वारे गे
णायनये नमः॥ वीं वटुकाय नमः॥ क्षीं क्षत्रपालाय नमः॥ यीं
योगिन्यै नमः॥ वलि॥ ॥पुन मूलेन त्रयाञ्जलि ३॥ पूर्ववत्॥
तुभालापूजा॥ निर्वाच्छाय॥ भगुनपूजा॥ जथाविधि॥ वलि मूले॥ च
न्दनादि छाय॥ धूपःदीय॥ विशेषनादीयबद्वालनं॥ सलिमेलास
अग्नि नस्ती॥ स्वधनयाउाव॥ घेलसबुलाईनासन॥ अग्नि छोयके

१ ध्वक्षिसीः नाहागुर्ईनालः व्याऊवकाय ॥ मन्त्रश्च ॥ ऐं रां रीं रूं श्रीं दीपब्र १
क्षालय २ हुं फट् स्वाहा ॥ ॥ मूलमन्त्रेन पात्रेनिधाये ४ ॥ श्रीं अर्घ
पालीरवनहायः फट् ४ ॥ अवगुण्ठनेः हुं ॥ ध्यानद्रष्टाः वं ॥ नाराच
यैः अस्त्रायः फट् १० ॥ ध्यानतयः पूर्ववट ॥ पाद्यादिनयः ॥ मूलना
श्यायाञ्जलि ३ ॥ वलि ॥ जापमूलेनः ह्लीं वगलामुखी सर्व्वदुष्टानां
वाचमुखं स्तंभय २ जिह्वा कीलय २ बुद्धिनाशय २ ह्लीं स्वाहा ॥ १०८
जपसमर्पनेः ॥ ॥ अथदीपदानेः ४ ॥ ऐं सर्व्वज्ञायमहावलपरा

क्रमाय ४ महाप्रचन्डाय ह्लीं वगलामुखी देवीई दंदीपय २ हान मम
शत्रून्दह २ भस्मीकुरु २ मम सर्व्वकार्याणि साधय २ रक्ष २ तुष्टि
पुष्टिवृद्धि देवनी समपयामि नम ४ ह्लीं स्वाहा ४ ॥ विशेषअर्घोदके
समर्पने ४ ॥ ॥ माडहल स्तोत्र ॥ कवचादिः पठे ७ ॥ ध्वमालकोस्तो
त्रयायः ॥ विशेषवगलास्तोत्रः ॥ मातर्भैरवी भद्रकाली विजये वारा
ही विश्वात्रये ॥ श्रीनित्ये समये मदेभ्शि वगले कामे भिवामे रमे ॥ मा
तंगि त्रिपुरे परापरतरे स्वर्गापवर्गप्रदे दासोहं भरणागत ४ करुणया
सर्व्वदा

विश्वेश्वरीत्राहिमाः॥ ॥दक्षिनाह्वायः॥वोपिपुजाः॥यज्ञजाग॥मु
द्रेह्वायः॥वोकनह्वायः॥आचार्ययूजादक्षिणाःपितवस्तविया
जधासर्वोः॥सगुनःमोहोनिह्वायः॥अभिषेकःचन्दनाद्याभिव
द॥तर्पणी॥समयतर्प्पणीः॥न्यासलीनःसुर्य्यासाक्षिथायः॥
निमाल्यपूजा॥ ॥क्षमस्व॥ ॥इतिश्रीपीठेश्वराम्नस्वस्तिदीपदा
नःविधिसमाप्त॥ ॥शात्रुपक्षमःफकराभउन्नमथ्वः॥ ॥ओं
ॐ नमः श्रीपीठेश्वरायैः॥हिमवन्तनयागौरीःकैलासेयाभि

लाञ्छया॥यद्यद्गिरिसदेवीःसाधकानुग्रहेछया॥१॥श्रीपार्वत्युव
च॥ ॥देवदेवमहादेवःभक्तानुग्रहकारक॥अनुविज्ञायामेः
कर्णाःश्रृनुसम्यगिदीवर॥२॥विशुद्धाकोलिकालोकेःयत्रकर्म्मप
रायणा॥तेषानिन्दाकरालोकेःवहकः४किदुर्जना॥३॥मनोवधि
विदग्धेतेःमृकुःकदुकलितिमिः४॥तेषासुविनासायःत्वयादे
वप्रकासिने॥४॥यैमेत्रावगलानुरव्याःसर्वकामसमृद्धिदा
४॥कववैश्यस्यामेत्रस्यःप्रकाशयविभोधुनी॥५॥यस्यस्मरणा

मात्रेणः नराणां निग्रहो भवेत ॥ आत्मनः सततं रक्षाः विरवाग्नि
विषुतं जितः ॥ ६ ॥ श्रुत्वा तु पार्वती वाक्यं ज्ञात्वा तस्य मनोगतं
॥ विहस्य नायरैश्वर्याः मधुमाध्वी निपूजयेत् ॥ ७ ॥ आदनक्व
वीदेवः कृपयादैटयानिधि ॥ ॥ श्रीभैरवो उवाच ॥ शृनुन
न्दु वगलामुख्याः कवचं सर्वसिद्धिदम ॥ ८ ॥ यस्य स्मरणमात्रे
णः वगलासुप्रसीदति ॥ ॥ ॐ अस्य श्रीपीताम्बरा वगलामु
खीकवचस्य महादेव ऋषिः ॥ पंक्ति छन्दः ॥ श्रीपीताम्बरा देव

ता ह्लीं वीजं स्वाहा शक्तिः सर्वकामार्थ शाधन विनियोगः ॥
॥ सर्वशिद्धिप्रदा प्राच्यां पातु मां वगलामुखी ॥ ९ ॥ पीताम्ब
रा तथाग्नेयां याम्यां माहिषमर्द्दिनी ॥ नैऋत्यां चण्डिका पातु
रिपुभिग्रहकारिणी ॥ १० ॥ पातु मां वैगदाहस्ताः —— वीभूकरा
नना ॥ वायव्यां पातु मां काली कौवेर्यां त्रिपुरा वटु ॥ ११ ॥ ऐंशान्यां भै
वी पातु पातु नित्यं सुरप्रिया ॥ ऊर्द्ध वागीश्वरी पातु मध्यमे ललि
ता वटु ॥ १२ ॥ अधस्मादपि मां पायात् द्वारा हि वक्रधारिणि ॥ मद्ध

कैपातु मे नित्यं श्रीदेवी बगलामुखी ॥१३॥ भालं पीताम्बरा पातु ने
त्रे त्रिपुरभैरवी ॥ श्रवणौ विजया पातु नासिका युगलं जया ॥१४
सारदा वदनं पातु जिह्वां वकुरेश्वरी ॥ कंठं रक्षतु रुद्राणी स्कं
धौ मे विन्ध्यवासिनी ॥१५॥ सुन्दरी पातु मे बाहोः पातु दुर्गा करौ भ
द्रा ॥ भवानी हृदयं पातु मध्यमे भुवनेश्वरी ॥१६॥ नाभिं पातु म
हामायाः कटिं कमललोचना ॥ गुह्यं मे पातु मातंगीः जानुनी
वापराजिता ॥१७॥ जंघे कपालिनी पातु चरणौ चंचलेक्षणा ॥
सर्वांगं पातु मे तारा योगिनी पातु मां सदा ॥१८॥ पृष्ठं पा
तु कौमारीः दक्षपार्श्वे शिवावतु ॥ रुद्राणी वामपार्श्वे तु स
र्वदेहेषु हेक्षता ॥१९॥ मनुनां सर्ववेदेषु रक्षावीजविनाशि
नी ॥ इत्येतत्कवचं दिव्यं धर्मकामार्थसाधनं ॥२०॥ गोपनी
यं प्रयत्नेन नकस्मै विनप्रकाशितं ॥ य इदं विमृयाद्देवः कव
चं मन्त्रमुखोदितं ॥२१॥ स च सर्वान्लभेत्कामान्‌ नात्र कार्या
विचारणा ॥ अपुत्रो लभते पुत्रं मूर्खो विद्यामवाप्नुयात् ॥२२

यस्मीदं प्रपठेद्देनतः कवचं भैरवोदितं ॥ तस्याश्रमत्रयो यातिः
यमस्य भवने शिवे ॥२३॥ इति श्री रुद्रयामरे भैरवोदितं श्रीवग
लामुखी कवच समाप्तम् ॥ ॥ ॥ ॐ नमः श्री हनुमं भैरवो याप्रः
द्दिति ॥ ॥ आचमन ॥ सूर्य्यार्घ ॥ गुरु नमस्कार ॥ ॥ न्यास ॥ अस्य
श्री हनुमं भैरव मंत्रः द्वादश नाम मंत्रस्य रामचन्द्र ऋषिरनुष्टुप् छन्दः
श्री हनुमं भैरव सदाशिवो देवता समस्त कामना सिध्यर्थं जपे
विनियोगः ॥ ॥ सर्वांगे ॥ ह्रौं ह्रां ह्रीं ह्रुं फट् अंगुष्ठाय फट् ॥ १ ॥ ॐ

ह्रौं ह्रां ह्रीं ह्रुं अंगुष्ठाभ्यां नमः ॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फट् तर्जनीभ्यां न
मः ॥ ॐ ह्रौं ह्रां ह्रां ह्रीं ह्रुं फट् मध्यमाभ्यां नमः ॐ ह्रौं ह्रां ह्रीं ह्रुं फट्
अनामिकाभ्यां नमः ॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फट् कनिष्ठकाभ्यां न
मः ॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फट् करतलपृष्ठाभ्यां नमः ॥ ॥ वक्त्रन्यास
॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फट् अस्त्राय फटः ॥ १ ॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फट् ऊर्द्ध्ववक्त्रा
यनमः ॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फट् पूर्ववक्त्रायनमः ॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फ
ट् दक्षिणवक्त्रायनमः ॥ ॐ ह्रौं ह्रां ह्रीं ह्रुं फट् उत्तरवक्त्रायनमः ॥

ॐ श्रूं क्रों ह्रीं हूं फट् पश्चिमवक्त्राय नमः॥ ॥हृदयादि जलपात्र
पूजा। गायत्री॥ ॐ हनुमन्ताय विद्महे अञ्जनीसूताय धीमहि। त
न्नो रुद्र प्रचोदयात्॥ ॥अर्घपात्रपूजा॥ आत्मापूजा॥ ॥मालि
नी पठेत॥ पंचबलि॥ नतो सोधन॥ ॥श्रीसम्यज्ञान। आवाहन त्रि
देवपूजा॥ आसन॥ आधार शक्ति। न्यादि॥ पेतास्ताय पादुकी॥
ध्यान॥ महाभैरी समुत्थाय। धावन्तीरावणी प्रति॥ पंचवक्त्र महातेजो ति
ह्रस्पभक्तं तु भक्षाणी॥ निंजति ह्रस्तौर्द्र ह्लजोवणो नीसमुत्थे नरः॥

रक्तारक्तारुणीरौद्र। कालानलकाजमोयमं ज्वलदग्निसमयती॥
सूर्यकोटिसमप्रभं। खगनादैर्महाभिदै। वह्निनेत्ररुद्ररूपिणः॥
ध्यानपुष्पं नम॥ ॥आवाहन॥ प्राणप्रतिष्ठा॥ ॐ आं ह्रीं ह्रीं हूं हनु
भैरवाय जिवईहाति ह्र ॐ आं ह्रीं क्रौं वो उमलः चक्षुश्रोत्रत्वक
जिह्वाघ्राणाई हागत्य सुखं चिरं तिष्ठन्तु स्वाहा॥ ॥स्नान॥ चन्दन
सिन्दुर। अक्षत। धूप। दीप। नैवेद्य नमः॥ ॥आचमनं नम॥ त्रयीज
लि ३॥ ॐ ह्रीं हूं हे हुं हं फट् ॐ श्रां क्रों ह्रीं हूं फट् ह्रीं ह्रीं हूं फट् २।४

ड्ग॥ बलि॥ ॥त्रिबीजली॥ह्रं पवनानन्दायस्वाहा॥खड्ग॰बलि
पूजायाय॥ ॥ॐ सुग्रीवनमः॥ॐ लक्ष्मनँ नमः॥ॐ जीबुवाणि
नमः॥ॐ कुमुदनमः॥ ॥अथ पत्रे वन्त्यादि पूजा॥ ॥पूर्वे
॥पांघीपुंपूँ पूर्वास्नायनमः॥दक्षिणे॥ क्रीं क्रूं दक्षिणायनमः
श्रं स्त्री स्त्रूं ऊर्ध्वास्नायनमः॥ॐ ह्स्म्ल्व्र्यूं पश्चिमास्नायन
मः॥ॐ ऐं उत्तरास्नायनमः॥गुह्यका ह्स्क्ष्म्ल्व्र्यूं लिकायनमः
ॐ ऐं ह्सौं सौं ऊर्ध्वास्नायनमः॥त्रिपुरायनमः॥चतुःपीठेस
पूजा॥ ॥यों जालन्धरपीठायनमः॥श्रीं ओड्यानपीठायनमः॥ॐ
क्रीं कामरूपीठायनमः ॐ पुं पूर्णागिरीपीठायनमः॥ ॥चतु
द्वारस॥क्षेत्रपाल॰बटुक॰गणा॰योग्नीपूजा॥त्रिबीजहि३॥ ॥ॐ ह्रीं
ह्रैं ह्रं क्रूं फट्॥ॐ क्षीं क्षौं ह्रीं क्ष्रूं फट्क्रौं ह्रीं ह्रूं फट्३॥खड्ग॥बलि॥
मुद्रा॥तर्पण॥हकार सकार॥ ॥निर्वानछाये॥त्वाकमहावलि
विये॥ ॥कामायाबलिहाये के॥ह्रं हनुमैरवाय॰शर्वसैन्यैः मा
रय२स्वाहा॥ॐ ह्रीं श्रीं ह्रैं ह्रीं फट्स्वाहा॥ ॥मनुयागुनामकाया

रुद्रिका·ग्रुका·माहामीस·मद्येपान·ध्याउार·होमयानेथा·धुप·दीप
जाप॥धा१०८॥१०॥जाके नामकायार·होमयाय॥मन्त्रप्रयोग॥ह्नूश्री
हा·ध्यह्मीम्·ह्नुंजुंह्नुं॥अथवारोगीजुयुर्वधकं·वशिहत्रअषिन·रा
मचन्द्रया·महाशीकह्नजुरवेलस·टयकागु·कुत्रकर्णीस्यात॥धप्र
योग·नृमाशायायेमते·धनह्नद्वयत्नोक्षेत्रुख॥ ॥गायत्रीन होमर्शं
त्रिसदयात॥ ॥धा१०॥लक्षमाटोपुरश्चर्णी॥पुष्पाजलि॥ओं ना रा
मचन्द्र हेयनेनन्द नन्दनाय स्वाहा॥गरुडतर्प्यायाभिजलसजग्रंथे

ये·रक्तचन्दनचोयायाउपूजायाये॥ ॥हनुभैरवयामूर्त्तिखरदा·लुधी
नाहाक॥खड्ग·खत्वांग·अंकुस·अक्षमाला·खड्गी॥त्रिशूल·पास·प
र्वत·मूजल॥ ॥रक्षाजग्र॥गदाहस्तुति·अग्नीज्वाला·वाहास्वाय

कार·पिकायार्ननय·ह्याउवर्णी·ह्याउवस्त्र·ह्मानपांशु
ग्नीज्वालापिकायार्ननये:॥ ॥पूर्ववक्त्र·गुह्नुर्वा॥
दक्षिणावक्त्र·नारसिंहनुसु॥पश्चिमवक्त्र·गरुड·पित
॥उत्तरवक्त्र·वाराह·रक्त॥उर्द्धवक्त्र·मतयावर्णी॥हनुरैभैया